M. T. B. COLLEGE, SURAT

Manuscripts Library

No. Ref.
Ser. 64

Title: Asadha. Shravana-Bhadrapada Vratam

	Āshāḍha-Shrāvana-Bhādra-pada Vratāni	Title
		Author
	(Bhavishyottara Purāna)	Editor
		Year, Vols.
		Publisher
64		Remarks

श्रीगणेशायनमः॥ अथआषाढश्रावणभाद्रपदामावास्याव्रतानिलिख्यंते॥ पुराकैलासशिखरेदेवदेवंमहेश्वरं ब्रह्माविष्णुसुरेंद्राश्चऋषिगंधर्वपन्नगाः॥ केचि
द्धायंतिन्त्यंतिकेचिद्वाद्यंतिशंभवे। तैःसहावसरेप्राप्तेसूतोवचनमब्रवीत्॥ २॥ सूतउवाच व्रतानिविविधान्याथजपहोमादिकंतथा धर्ममार्गाननेकांश्चत्वया
ख्यातापितामह ३ पोलिकायाश्चमाहात्म्यंतन्मेब्रूहिसमासतः पितामहउवाच आसीत्पुराकृतयुगेक्रमंतोनामवैनृपः ४ तस्यपुरोहितोजातोदेवशर्मा
द्विजोत्तमः वेदवेदांगविदुषोधनीनबहुबांधवः ५ तस्यैकादुहिताजातासगुणासुरूपिणी कदाचिद्दैवयोगेननारदोतत्रचायुयुः ६ अर्घ्यंपाद्यंततोद
त्वापूजांकृत्वाविधानतः तस्यभार्यागुणवतीसाष्टांगंप्रणतोदितं ७ स्त्र्योवाच स्वामिन्त्वत्प्रसादेनकन्यारत्नंसुलभ्यते नामकर्मादिकंसर्वंकथयस्वाशुना
रद ८ नारदउवाच तपस्विनीसुशीलाचधर्मसंतानवर्धिनी यावच्चंद्रस्थितेसूर्येतावत्कीर्तिप्रवर्धिनी ९ विवाहोर्ध्वपलार्धेनयस्याभर्त्तानजीवति ए
वंश्रुत्वागुणवतीदुःखिताबहुमानसं १० पत्युग्रेवाथकथितंवृत्तांतंमुनिभाषितं एवंश्रुत्वामुनेर्वाक्यंदेवशर्मासुदुःखितः ११ कस्मैदेयामयाकन्यायस्मोद्वा
हंनकारयेत् पितुर्गृहेपिवसतिसाकन्यायौवनेसति १२ कन्योवाच प्रपृच्छमातरंकन्याममोद्वाहंनकारयेत्। कन्यावाक्यंतुयच्छ्रुत्वामातातस्यासुदुःखिता १३
माभैउवाच मुनेर्वाक्यंसमग्रेणवृत्तांतंकथयामिते एवंश्रुत्वातुसाकन्यापतत्वासुवभूतले १४ आश्वासिताचयाकन्यादुःखिताबहुमानसं ततोपदेशितंतस्यै
विष्णोराराधनंशुभं १५ यावद्द्वादशवर्षाणिचरंतितपउत्तमं कदाचिद्दैवयोगेनमार्कंडेयोत्रविद्यते दृष्ट्वासकन्यकारूपंध्यात्वानारायणंहरिं १६ मार्कंडेयउवाच

मार्कंडेय बाल्ये वै तपसंपन्ने कोहेतुः कन्यचिंतनं तन्मे वद समाग्रेतु वरासितपङ्पदं १७ कन्योवाच नारदोक्तव्रतं तेन समग्रं कथयामि ते १८ ज्ञात्वा सर्वं मुनींद्रो वै प्रतिवचनमब्रवीत्
मार्कंडेय० स्त्रीणां भर्तापरो देवः स्त्रीणां भर्तापरं व्रतं १९ स्त्रीणां भर्तापरो धर्मः लग्नाजन्म निरर्थकं स्त्रियो भर्तारं सेव्यं ते स्त्रियो भर्तृव्रतं परं २० स्त्रिया भर्त्ता न सेव्येत दुः
खं जन्मनि जन्मनि जीविते सेवनं कार्यं मृते तत्पद्मने चरेत् २१ तपांते वा व्रतांते वा स्नानदानांतराणि च संकल्यात्तत्र कुरुते भर्ता प्रीतो जनार्दनः २२ दीपोपभुर्मुनींद्रो श्रु
भर्त्तत्वां प्रयच्छति मार्कंडेयोपदेशेन कुमारी पितुरालयं २३ संपूज्य गणनाथं च गंधपुष्पाक्षतैर्युतैः पुष्पमालाप्रकर्तव्या गौरजे समये शुभा २४ त्वमेव साक्षिभग
वन्न भर्त्ता दीपो प्रयच्छति निमिषार्द्धमात्रेण दीपो देवालयं गतः २५ विस्मिता सा तदा कन्या दुःखिता बहुमानसं २६ स्मरंती न ऋषेर्वाक्यं पश्चाद्दाहं करोति वै पुष्प
मालाप्रकर्तव्या वृषकंठे नियोजयेत् कुलायं न विजानीयाद्धूपो देवालयं गतः २७ तदा खेदसमुत्पन्नदुःखमूर्छां गता तु सा ज्वरदाहबहुक्लेशं कामबाणेन पीडिता २८
नागेंद्रनाम मुनयो कन्यार्थं तत्र वायुयुः अर्घ्यं पाद्यं ततो दत्वा ऋषिपूजां यथाविधि २९ पश्चागमने हेतुं तन्मे ब्रूहि तपोधन नागेंद्र उवाच० विवाहार्थी वितां कन्यां
तन्मे देहि महामुने देवशर्मोवाच० नैव देया मया कन्या यतो दाहं न कारयेत् ३० नारदोक्तं हि यत्सर्वं वृत्तांतं कथयामि ते इत्युक्त्वा हि पूर्वजातं सर्वं तस्मै निवेदयेत् ३१
नागेंद्र उवाच असत्यभाषणं चैव त्रैलोक्यगमनं तथा नृत्यगीतविनोदं च नारदस्य स्वभावतः ३२ देवशर्मोवाच अहं पापोपदेशेन नो लिप्यामि कदाचन ३३ नासत्यं श्रीशिव
हि ऋषेर्वाक्यं नारदस्य तु भाषितं नागेंद्र उ० अन्नदानादिदानानि योद्द्याद्व्रतपोधन ३४ मृतो वा जीवो वापि तस्य दोषो न लिप्यते कन्यार्थिने त्वया प्राज्ञ १
देयं दानार्थिने प्रभो याचको निर्गतो यस्य तस्य धर्मः क्षयं गतः विद्यार्थप्रार्थितो विद्यां प्रथमं यः प्रयच्छति ३६ कन्यार्थिप्रार्थितो कन्यां तस्य पुण्यम

नंतकं ३६ कन्योद्वाहकृतो योसौ यथाशक्त्या यथाविधि उद्धरेत्समगोत्राणि कुलमेकोत्तरं शतं ३७ श्रुत्वा नागेंद्रवचनं देवशर्मा द्विजोत्तमः सुशीलां च गुणवतीं कन्यां तस्मै ददौ
किल ३८ वेदोक्तविधिना सम्यक् विवाहमकरोत्शुभं ब्रह्माविष्णुमहेशाद्यैर्ऋषिवृंदसमायया ३९ किंचिद्दायादिकं दद्यान्नागेंद्र परितुष्टये पंचमे वासरे प्रा
प्ते वंशपात्रं प्रयच्छति ४० देवशर्मा गुणवती हृष्टा तु बहुमानसं पंचमे मासि संप्राप्ते सुशीला गर्भधारिणी ४१ नागेंद्रो मृतो पश्चाच्छोको भवति दारुणः
स्वशीला च गुणवती तस्य कर्म समाचरेत् ४२ गोदानं वस्त्रदानं च कांचनं रजतं तथा ब्राह्मणाय प्रदास्यामि भर्त्ता मुक्तिमवाप्नुयात् ४३ तद्गर्भदिवसे पूर्णे
सुतास्तं सुशीलिका दृष्ट्वा पुत्रं सुशीला वै हृष्टा तु बहुमानसं ४४ दशमे वासरे प्राप्ते देवशर्मा समाययुः जातकर्मादिकं नामकर्मादिकं चरेत् ४५ ब्रा
ह्मणान्भोजयेद्द्याद्वस्त्रालंकारभूषणैः सवत्सा गौः प्रदातत्र सहिरण्या सदोहिनी ४६ तस्य नामाभिधानं च नरेंद्रेति प्रतिष्ठितं अष्टमे वत्सरे प्रा
प्ते व्रतस्थो यत्र विद्यते ४७ यावद्द्वादशवर्षाणि वेदाभ्यासं करोति सः वेदवेदांगविदुषो शास्त्राणि गणितं तथा ४८ विवाहमकरोत्सो वा अग्निहोत्रादि
कं चरेत् आत्मनो मुक्तिकामोपि पितॄणां तृप्तिहेतवे ४९ फल्गुतीर्थं गतो सो वै ततः श्राद्धं प्रवर्तते पिंडं दद्यात्तु समये विपर्यं तत्र भवति ५० पिंडस्थानत्रयं दृष्ट्वा
कस्य पिंडः प्रदीयतां नरेंद्र उवाच सुशीले शिलमादाय ममाग्रे वद सत्वरं ५१ प्रथमं दीपमालोक्य द्वितीयं वृषभं तथा तृतीयं हस्तमालोक्य कस्मै पिंडः प्र
दीयतां ५२ तदा सा विस्मिता चैव सुशीला कुलमंडना सुशीलोवाच तपश्चर्यं गुहारण्ये मार्कंडेयो त्र विद्यते ५३ तत्रोपदेशितं तेन तवाग्रे कथयामि ते

गणवीव्रतं त् प्रथमोदीपमतोमेद्वितीयोवृषभस्तथा ५४ ततीयोमानवश्चेतिधर्मायोदीप्तकारणात् मार्कंडेयमुनींद्रेणकथितंमांनसंशयः ५५ निमंत्रितास्तुमुनयो
वसिष्ठोगौतमादयः श्रुत्वास्फशीलयोर्क्रहियद्विवार्यदृढमानसे ५६ वसिष्ठउ॰ मार्कंडेयमुनींद्रेणसत्यंतद्ववदाभिते पितृणांमुक्तिकामेननराणांहितका
म्यया ५७ ~~पितॄणांमुक्तिकामेननराणांहितकाम्यया~~ ऋषिगंधर्वलोकानांधर्मसंतानवर्धनं आदौदीपःप्रपूज्येववृषभःस्तदनंतरं पितृंश्चैवापराह्णे वै
२ जलेमन्नंप्रदीयतां ५९ नरेंद्रउवाच कस्मिन्कालेतिथौकस्यांकिंदानंकस्यपूजनं तन्मेब्रूहिसमासेनवसिष्ठमुनिसत्तम ६० वसिष्ठउ॰ आषाढेमा
स्यमावास्यांप्रदोषव्यापिनींतिथिं दीपपूजाप्रकर्तव्यापुत्रपौत्रादिवृद्धये ६१ आषाढेमासिसंप्राप्तेयःकुर्वंतिव्रतोत्तमं तस्यनैवावलालक्ष्मीरंतेमु
क्तिमवाप्नुयात् ६२ नकरोतियदामूढंआषाढेव्रतमुत्तमं तस्याःकुलंक्षयंयातिवसतेनरकार्णवे ६३ श्रावणेमास्यमावास्यात्रिमूर्तायाप्रशस्यते म
न्मयींप्रतिमांकृत्वावृषपूजाप्रयत्नतः ६४ दानंदद्यात्प्रयत्नेनजलमन्नादिकंशुभं पशुपूजाप्रशस्येतमध्याह्नव्यापिनींतिथिं नंदाविद्धाप्रकर्त
व्यातस्यांश्रीरचलाभवेत् ६५ त्रिमुहूर्तोनापूर्वास्यात्रिमुहूर्ताधिकापरा पशुपूजांप्रकुरुतेमुच्यतेकर्मबंधनात् ६६ नभस्येमास्यमावा
स्यांपितृतर्पणमाचरेत् उद्धरेत्सप्तगोत्राणिकुलमेकोत्तरंशतं ६७ ब्राह्मणःक्षत्रियोवैश्यःशूद्रोंत्यानवर्णजः व्रतमाचरितोयस्तुतस्यश्री ही २
रचलाभवेत् ६८ नकुर्वंतिव्रतंयेवैत्रिविधंपापनाशनं तेनरानरकंयांतियावच्चंद्रदिवाकरौ ६९ मार्कंडेयोपदेशेनसुशीलासुखमाप्नुयात्। २

कथितंचवसिष्ठेननरेंद्रोव्रतमाचरेत् ७० येनव्रतप्रभावेणलभ्यतेसुखसंपदः अंतेमुक्तिमवाप्नोतिदृश्यतेद्याप्यंबरे ७१ नक्षत्राणांच
संस्थानेपूर्वाभाद्रपदश्रयाः एवंव्रतंमहापुण्यंत्रिविधंपापनाशनं ७२ आषाढेमास्यमावास्यांप्रदोषव्यापिनींतिथीं दीपपूजाप्रकर्तव्या
पुत्रसंतानवर्द्धिनीं ७३ श्रावणेमास्यमावास्याद्विमुहूर्ताधिकापरा पशुपूजांप्रशंसंतिधनसंपत्प्रदायिनीं ७४ नभस्येमास्यमा
वास्यांतुरीयेसमुपस्थिते पितॄणांतर्पणंज्ञेयंतद्दत्तंचाक्षयंभवेत् ७५ एवंव्रतंमहापुण्यंपवित्रंपापनाशनं अपमृत्युविनाशा
यअंतेसायुज्यमाप्नुयात् ७६ पुरुषोवास्त्रियोवापियेकुर्वंतिव्रतोत्तमं तेषांसंतानवृद्धिश्चधनधान्यादिकंभवेत् ७७ एवंव्र
तंमहापुण्यंनकरोतिनरोधमः हसंतियमदूतास्तंनरकंप्रतिपद्यते ७८ नकरोतियदानारीव्रतानामुत्तमंव्रतं सप्तजन्मभ
वेद्वंध्याविधवामृतवत्सका ७९ भुक्तिमुक्तिप्रदंचैवपितॄणांतृप्तिदायकं सर्वव्रताधिकंश्रेष्ठंसर्वपापप्रणाशनं ८० सर्वतीर्थकरंसत्यंसर्वदानफलं
लभेत् अंतेमुक्तिभवेत्तस्यसर्वधर्मार्थसाधकं ८१ इदंव्रतंचमाहात्म्यंशृण्वंतिचपठंतिच धनधान्यसमृद्धिंचअंतेसायुज्यमाप्नुयात्॥ ८२ ॥
इतिश्रीभविष्योत्तरपुराणेआषाढश्रावणभाद्रपदमासुदीपवृषभपितृपूजनव्रतमाहात्म्यंसमाप्तं॥ इदंपुस्तकंजडियानाम॥ ॥

२ ॥ इतिगणवीअमावास्याव्रतमाहात्म्यंसमाप्तं ॥१